DPN 6860

Title : शरभकवच / ŚARBHA KAVACA

Run. No. 7585 | Cat. No. | Micro. No.

Subject Stotra | Religion : **Hindu** / Bauddha

Language : **Skt.** / New. / Nep. / Skt.- New. / Maith.- New. / New.- Nep. /

Size in cms. | Folios 10 | Lines (in a page) 8

Compl. / **Incompl.** | Chapt. / act /

Author / translator Vallabharāma | Scribe / donor

Date: NS / SS / VS / KS | Ruler / place

Script : New. / **Dev.** / Bhuj. / Ran. / | Illus. : on the margin. Śarabhaka.

Material : palmleaf / **paper** / thyasaphu / | Folios 1 – 34 are missing.

Condition : fine / damaged by worms, rats, water /

Beginning, **colophon**, post-colophon :

इति श्रीमदाकाश भैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे श्रीशंवर-विरचिते श्रीशरभोपाक्षिराजाख्य कवचं नाम एकोन चत्वारिंशपटल समाप्त: ॥

दाशाक्षिभीतिर्व्वहंतं॥शंखंखेटंकपालंसधनुहलमणिश्रोटदानादिहस्तं॥सिंहारिंश्रा
लुवेशंनमतरिपुजनप्राणसंहारदक्षं॥ॐनमोभगवतेविश्वशरीरायपंचमुखभंजना
यप्रणतार्त्तिविनाशाय॥उग्रायउग्रदंष्ट्रायउरगमणिभूषणाय॥उचण्डकोलाहलाय
सर्व्वलोकप्रियाय॥सर्व्वभूतनिवारणाय.शतध्वतिकपालमालालंकृताय॥शाईल
चर्म्मवसनाय.शलभशालुवाय॥सूर्य्यसोमाग्निलोचनाय॥दुर्न्निवारणाय॥दूर्वादलश्या
मलाय.दुरितहराय॥ॐश्रींक्लींप्रींसर्व्वभूतान्याकर्षयाकर्षय॥सर्व्वग्रहानाकर्षयाकर्ष
य॥अतल.वितल.सुतल.तलातल.भूतल.रसातल.पातालादाकर्षयाकर्षय॥भूर्भुव.
स्वर्म्महर्जनतपःसत्यलोकादाकर्षयाकर्षय॥श्वन्नमयादाकर्षयाकर्षय॥प्राणम

शर
३५

यादाकर्षयाकर्षय॥मनोमयादाकर्षयाकर्षय॥विज्ञानमयादाकर्षयाकर्षय॥नन्द भक
मयादाकर्षयाकर्षय॥ममसकलकुटुंवस्य शरीरे वर्त्तमानवर्त्तिष्यमाणापस्मारेषि
नशाल्यसहितसमस्त॥दुष्टभूतप्रेतपिशाचादीन् क्षिप्रं वौषट् आकर्षयाकर्षय॥ ॐ
ह्लौं ह्रीं क्रों भूतग्रह.पिशाचग्रह॥यक्षग्रह.राक्षसग्रह.सर्प्पग्रह.दर्प्पग्रह.अपस्मारग्रह॥
भीमग्रह.ब्रह्मराक्षसग्रह॥वेतालग्रह.कौमारग्रह.पातालग्रह॥स्त्रीग्रह.पर्व्वग्रह. ग्रहः
पापग्रह.पापविग्रमग्रह॥बालग्रह.चातुर्थिकग्रह.मिथ्याग्रह॥मिथ्याभिसापग्रह. ३५
घटिकाग्रह.यामग्रह॥दिवाचरग्रह.निशाचरग्रह.होरात्रग्रह॥सप्तरात्रग्रह.पक्षग्रह
मासग्रह॥मण्डलग्रह.त्रिमासग्रह.षण्मासग्रह.वत्सरग्रह॥अनुभोगग्रहा.अनुसार

ग्रहा.भिचारग्रहा.भिमुक्तग्रह॥जीवग्रह.दावाग्रह.वातग्रह.पावकग्रह॥ज्वरग्रह.रो
रोगग्रह.चेतनग्रह॥स्फोटकग्रह.दंशकग्रह.वांतिकग्रह.भ्रांतिग्रह.हिकाग्रह॥संघा
टग्रह.सन्निपातग्रह॥शोषणग्रह.अविद्याग्रह.विज्ञानग्रह॥लौकिकग्रह.वैदिक
ग्रह.अन्नग्रह॥राजग्रह.कीटग्रह.लूटग्रह.सात्विकग्रह॥सर्व्वसान्त्रिकग्रहा॥आवे
शयावेशय॥आधारयावेशयावेशय॥प्रवेशयाप्रवेशय॥दीप्तंप्रवेशयाप्रवेश
य॥लोभयलोभय॥कंपयकंपय॥सकललोकं कंपयकंपय॥सकलशैलंचाल
यचालय॥सकलदिशंरोधयरोधय॥सकलपदंविध्वंसयविध्वंसय॥सकलास
निंपातयपातय॥सकलसागरंक्षोभयक्षोभय॥सकलनदीः शोषयशोषय॥स

शा र
३६

कलरिपुं नमर्दय मर्दय॥ सकलशत्रुशेनां ध्वंसय ध्वंसय॥ श्रौँ श्रीँ क्लीँ क्रीँ ह्रूँ मोह
य मोहय॥ भ्रामय भ्रामय॥ भीषय भीषय॥ सर्व्वभूतग्रहं भीषय भीषय॥ वलेषु सर्व्व
पदादिसर्व्वसार्व्वत्रिकग्रहं भीषय भीषय॥ ॐ क्रीँ कुँ वंधय वंधय॥ ग्लौँ ग्लौँ स्तंभय
स्तंभय॥ क्रौँ क्रौँ क्रोटय॥ रँ रँ प्रँ दाहय दाहय॥ हँ क्रौँ ठँ वँ जुँ संश्रावय संश्रावय॥ सर्व्व
संहारकारणाय शालुवपक्षिराजाय चण्डवातादिवेगाय॥ श्रैँ श्रीँ यँ यँ संक्रामय सं
क्रामय॥ खँ खँ रुंधय रुंधय॥ ताडय ताडय॥ पातय पातय॥ क्रोशय क्रोशय॥ कुर्द
य कुर्दय॥ रोदय रोदय॥ स्रौँ क्रौँ स्रंधय स्रंधय॥ भद्रः भद्रकाली दुर्गा कलित पक्ष
द्वयाय॥ प्रँ रवँ क्रौँ उच्चाटय उच्चाटय॥ हं परमन्त्र भेदनाय॥ रँ रँ रँ क्रौँ परतन्त्र विच्छेद

भ क

शा भः
३६

नाय॥ हनय हनय॥ कालानल भैरवाय शूलोदरोरस्थलाय॥ नाशय नाशय॥ सर्व्वभू
तग्रहं नाशय नाशय॥ वलेषु सर्व्वसार्व्वत्रिकग्रहं नाशय नाशय॥ ऐँ ईँ व्याधिकारकोह
द्वयाय॥ सर्व्वशत्रुन्मारय मारय भक्षय भक्षय॥ क्रीँ ह्रूँ फट् क्लीँ श्रीँ क्लीँ शरणागतवत्स
लाय सामगानप्रियाय चन्द्रशेखराय॥ अथर्व्वणपरायणाय अमृतोद्भव भाषणाय॥ श्रीँ
क्लीँ श्रीँ संतानसिद्धिप्रदाय॥ श्रीँ क्लीँ क्रीँ सर्व्वसंमोहनाय सर्व्वमायां मोचय मोचय॥ ऐँ ऐँ
सँ कालकालाय भाषां ज्ञापय ज्ञापय॥ जूँ सर्व्वरोगं हरणाय॥ ह्रूँ पँ जनय जनय॥ विज्ञानं
दापय दापय॥ हँ हँ वामदेवाय आत्मज्ञानं दर्शय दर्शय॥ श्रौँ क्रीँ ह्रूँ फट् क्लीँ श्रीँ क्रीँ अभि
ष्टं देहि देहि स्वाहा॥ श्रीँ ॐ पक्षिराजाय निशितकुलिशवरणखाय अनेककोटिवला

शर
३१

ण्डकपालमालालंकृताय॥सकलकुलमहानागभूषाय.नृसिंहगर्वाग्निर्वापका
रणाय॥सकलरिपुरंभाटविमोटनमहानिलाय॥शलभसालुवाय॥क्रौँ क्रौँ हूँ प्र
वेशय प्रवेशय॥रोगग्रहं वंधय वंधय॥वालग्रहं वंधय वंधय॥पक्षग्रहं वंधय वं
धय॥भाषय भाषय॥मोहय मोहय॥कंपय कंपय॥वंधय वंधय॥भूतग्रहं वंधय
वंधय॥पिशाचग्रहं वंधय वंधय॥राक्षसग्रहं वंधय वंधय॥तापग्रहं वंधय वंध
य॥चातुर्थिकग्रहं वंधय वंधय॥भीमग्रहं वंधय वंधय॥यापस्मारग्रहं वंधय वं
धय॥उन्मत्तग्रहं वंधय वंधय॥ब्रह्मराक्षसग्रहं वंधय वंधय॥ज्वालाग्रहं वंधय
वंधय॥ज्वालामुखग्रहं वंधय वंधय॥तापग्रहं वंधय वंधय॥नमोहारग्रहं वंधय

भक

शरभः
३१

वंधय॥भूचरग्रहं वंधय वंधय॥खेचरग्रहं वंधय वंधय॥कूष्माण्डग्रहं वंधय वंधय॥स्त्री
ग्रहं वंधय वंधय॥विक्रमग्रहं वंधय वंधय॥सुतक्रमग्रहं वंधय वंधय॥प्रेतग्रहं वंधय
वंधय॥पिशाचग्रहं वंधय वंधय॥आवेशग्रहं वंधय वंधय॥नावेशग्रहं वंधय वंधय
क्रौं ह्रीं त्रोटय त्रोटय॥नाशय नाशय॥सर्वदुष्टान्नाशय नाशय हुँ फट् स्वाहा॥आलेख्यं
वह्निं वहिरष्टशूलं मध्ये च मायां त्रिशिखान्तराले॥साध्यावृतं सर्वजयोपयोगं शंक्षोभ
णं च क्रममोघवीर्यम्॥रहस्यं शृणु देवेशी सर्वरक्षणमद्भुतं॥शरभं कवचं नाम्ना चतुर्व
र्गफलप्रदं॥शलभः शाल्वराजाख्य कवचस्य सदाशिवः॥ऋषिछन्दोस्य जगती प्रोच्य
ते सरभेश्वरः॥देवता प्रणवो वीजं प्रकृति शक्ति रुच्यते॥कीलकं पक्षिराजेति सर्वरक्षा

शा.र
३८

करोविभुः॥ परप्रयोगशान्त्यर्थे सर्वशत्रुनिहन्तये॥ चतुर्वर्गार्थसिध्यर्थे विनियोगस्य
भावना॥ ॥अथ ध्यानं॥ रत्नाभं सुप्रसन्नं त्रिणयनममृतो मन्त्रभाषाभिरामं॥ कारु
ण्यांभोधिमीसं वरदमभयदं चन्द्ररेखावतंसं॥ शंखाधानारिखलासाप्रतिहतविधि
नो॥ भासमानात्मभासा सर्व्वसंज्ञालुवेशं प्रणतभयहरं पक्षिराजं नमामि॥ श्रीशिवपु
रतः पातु मायाधीशस्तु पृष्ठतः॥ पिनाकी दक्षिणे पातु वामपार्श्वे महेश्वरः॥१॥ शिखा
ग्रं पातु मे शंभुर्निटिलं पातु शंकरः॥ इश्वरो वदनं पातु भ्रुवोर्मध्ये पुरान्तकः॥२॥ ध्रुवौ
पातु मम स्थाणुः कपर्दी पातु लोचने॥ शिवो मे श्रोत्रयोः पातु वागीशः पातु लंविकां॥३॥
नासायां मे हषाहृष्टो नासाग्रं वृषभध्वजः॥ स्मरारिः पातु नाल्वौतु ल्योष्ठयोर्मे ऋवसलः

भक

रामः
३८

॥४॥ पातु मल्लुं जयो दन्तान्धिवुकं पातु भूतराट्॥ परमेशः कपालौ मे त्रिकं पातु कपाल
भृत्॥५॥ कण्ठं पशुपतिः पातु शूलि पातु हनुर्मम॥ स्कन्धयुग्मं हरः पातु धूर्जटिः पातु मे
भुजौ॥६॥ तुजे हृदयं महादेव इशानो मम कूर्पकं॥ तुष्टिसंधी जगन्नाथः प्रकोष्ठे चन्द्रशे
खरः॥७॥ मणिवंधे त्रिशूली मे भीमः पातु करस्थलं॥ करपृष्ठं मृडः पातु रुद्रोंगुष्ठद्वयं
मम॥८॥ उमासहायस्तर्जन्यौ मर्ग्गो मे पातु मध्यमे॥ अनामिके करालास्यः कालकण्ठः
कनिष्ठके॥९॥ गंगाधरोंगुलीपर्वी एवं प्रमेयो नखाणि मे॥ वंशोत्तरस्तु रुषः पातु कुक्षौ दक्षा
ध्वरान्तकः॥१०॥ अघोरो हृदयं पातु वामदेवः स्तनद्वयं॥ नीलहृग् जठरं पातु नाभिं नारा
यणाक्षयः॥११॥ कुक्षिं प्रजाकरः पातु कुक्षिपार्श्वौ महाबलः॥ मेघोजातः कटिं पातु पृष्ठ

शार
३९

भागं तु भैरवः॥१२॥ मोहनो जघनं पातु गुह्यं मम जितेन्द्रियः॥ उर्ध्वरेता लिंगदेशे वृष
णं हृषभध्वजः॥१३॥ ऊरुयुग्मं भवः पातु जानुयुग्मं भवांतकः॥ श्रौंकारः पातु मे जंघे
फट्कारो मम गुल्फके॥१४॥ षड्क्षरः पादपृष्ठे मे क्षद्धारो ध्रुणोतु मे॥ स्वाहाकारोंगु
लीपार्श्वे स्वधाकारोंगुलीश्च मे॥१५॥ त्वचितः सर्व्वसंधीन्मे रोमकूपे नृसिंहजित्॥ त्वचं
पातु मनोवेगः कालजिद्रुधिरं मम॥१६॥ पुष्टिदः पातु मे मांसं मेदो मे स्खलितरोगहृत्॥ स
र्वात्मास्थिचयं पातु मज्जां मम जगत्प्रभुः॥१७॥ शुक्रं हृष्टिकरः पातु बुद्धिं वाचामधीश्व
रः॥ मूलाधारं तु जं पातु भगवान्शरमेश्वरः॥१८॥ स्वाधिष्ठानजमः पातु मणिपूरं हरी
प्रियः॥ अनाहतं शालुवेशो विशुद्धं वीजनायकः॥१९॥ सर्व्वज्ञानप्रदो देवो ललाटं मे स

भैक

रामः
३९

दाशिवः॥ ब्रह्मरंध्रं महादेवः पक्षिराजो खिलाकृतिं॥२०॥ सर्व्वलोकवशीकारः पातु
मां सर्व्वगर्व्वजित्॥ वज्रमुष्टिधरो भीतिहृत्कः कालाभ्रसन्निभः॥२१॥ विजयासहितः पा
तु वैन्द्रीं ककुं मम ग्निजित्॥ शक्तिशूलकपालासिहस्तः सौदामिनीप्रभः॥२२॥ जयाश्रुतो
महाभीमः पातु वैश्वानरीं दिशं॥ दंडाग्निमुशलं शूलं पाशांकुशकरांबुजः॥२३॥ यमां
तको जितायुष्को दक्षिणां पातु मे दिशं॥ खड्गपेताग्निपरशु हस्तः शत्रुविमर्दनः॥२४॥
अपराजितया युक्तः सदाव्यान्नैऋतीं दिशं॥ पाशांकुशधनुर्बाणपाणिः श्रोणितमुखाग्र
जः॥२५॥ हरिद्राभो निशां पायाद्वारुणीं दिशमात्मजित्॥ ध्वजाग्रैकवचोदारत्नुजो दु
र्गायुतः खगः॥२६॥ वायुवेगः शिवः पातु वातातिं मारुतीं दिशं॥ गदाक्षसुग्वराभीति

शार
३९

भागं तु भैरवः ॥१२॥ मोहनो जघनं पातु गुदं मम जितेन्द्रियः ॥ ऊर्ध्वरेता लिंगदेशे वृष
णं वृषभध्वजः ॥१३॥ ऊरुयुग्मं भवः पातु जानुयुग्मं भवान्तकः ॥ श्रीं कारः पातु मे जंघे
फट्कारो मम गुल्फके ॥१४॥ वषट्कारः पादपृष्ठे मे क्षट्कारो घ्रिणोस्तु मे ॥ स्वाहाकारोंगु
लीः पार्श्वे स्वधाकारोंगुलीश्च मे ॥१५॥ त्वचितः सर्वसंधीन्मे रोमकूपे नृसिंहजित् ॥ त्वचं
पातु मनोवेगः कालजिद्रुधिरं मम ॥१६॥ पुष्टिदः पातु मे मांसं मेदो मे स्वस्तिरोगहृत् ॥ स
र्वात्मास्थिचयं पातु मज्जां मम जगत्प्रभुः ॥१७॥ शुक्रं सृष्टिकरः पातु बुद्धिं वाचामधीश्व
रः ॥ मूलाधारं तु जं पातु भगवान् शरभेश्वरः ॥१८॥ स्वाधिष्ठानजमः पातु मणिपूरं हरी
प्रियः ॥ अनाहतं शालुवेशो विशुद्धं वीजनायकः ॥१९॥ सर्वज्ञानप्रदो देवो ललाटं मे सदा

भैक

राम:
३९

दाशिवः ॥ ब्रह्मरंध्रं महादेवः पक्षिराजोखिलाकृतिं ॥२०॥ सर्वलोकवशीकारः पातु
मां सर्वगर्वजित् ॥ वज्रमुष्टिधरो भीतिहृत्सः कालाभ्रसन्निभः ॥२१॥ विजयासहितः पा
तु चैन्द्रीं ककुभं मम मन्निजित् ॥ शक्तिशूलकपालासिहस्तः सौदामिनीप्रभुः ॥२२॥ जयायुतो
महाभीमः पातु वैश्वानरीं दिशं ॥ इडाग्निमुशलं शूलं पाशांकुशकरांबुजः ॥२३॥ यमां
तकोजितायुक्तो दक्षिणां पातु मे दिशं ॥ खड्गपेताग्निपरशुहस्तः शत्रुविमर्दनः ॥२४॥
अपराजितयायुक्तः सदाव्यान्नैर्ऋतीं दिशं ॥ पाशांकुशधनुर्बाणपाणिः शोणितमुखाग्र
जः ॥२५॥ हरिद्राभो दिशं पायाद्वारुणीं दिशमात्मजित् ॥ ध्वजोग्रैकवचोदारस्तुजोदु
र्गायुतः खगः ॥२६॥ चण्डवेगः शिवः पातु वातातिं मारुतीं दिशं ॥ गदाक्षस्रग्वराभीति

हार
४०

करां भोजः शिवासुतः ॥२७॥ कनकांभो महातेजोः पातु कौवेरिकीं दिशं ॥ त्रिशूलाहि
कपालाग्निदोस्थलो विश्वयासुतः ॥२८॥ भस्मोद्धूलितसर्व्वाङ्गो दिशं पात्वपराजिता
॥ जपाक्षपुस्तकांभोजे कमण्डलु करांबुजः ॥२९॥ ऊर्ध्वं पातु गिरापुत्रः सर्वभूतहिते
रतः ॥ शंखचक्रगदाभीति हस्तपद्मायुतो व्ययः ॥३०॥ नीलांजनद्युतो नीलः पातालं पात्व
नारतं ॥ अनुक्तो विदिशिः पातु साहुवो नारसिंहजित ॥३१॥ शरभः पातु संग्रामे युद्धे वै
रिकुलांतकः ॥ सर्व्वैसौ नाम्यद पातु जाग्रत्स्वप्नसुषुप्तिषु ॥३२॥ सर्व्वसंपत्प्रदः पातु धन
धान्यादिकं मम ॥ संतानदः सुतं पातु शत्रोणाशुः करोति शं ॥३३॥ बंधूनहृद्धिकरः पा
तु गृहं मम वशीकरः ॥ ग्रामं ग्रामेश्वरः पातु राज्यं मम दिगंबरः ॥३४॥ राष्ट्रं शान्तिकरः

नक

राम:
४०

पातु राजानं धर्म्मदायकः ॥ मार्गे दक्षहरः पातु मर्म्म कर्म्मणि भैरवः ॥३५॥ बटुकः पा
तु मे सर्व्वमवस्थात्रितयेषु च ॥ स्पृशन्पश्यन्जपन्कृत्वा प्रतिस्थानं समाहितः ॥३६॥
प्रार्थयेदखिलं श्वेष्टं हृदिस्थं सालुवेश्वरं ॥ ये ग्रामघातकाः क्रूराः कपटा दोषिका भय
॥३७॥ तस्करा राक्षवः क्रूरा पक्षाशकाः प्रसाधिनः ॥ छद्मचारा विदग्धश्चा दिवाचरनि
शाचराः ॥३८॥ ते सर्व्वे पक्षिराजस्य पक्षपातपराहताः ॥ स्त्रीबालसहिताः क्षिप्रं पितृमातृ
कुलांतकाः ॥३९॥ भग्नविज्ञागतस्थाना यांतु देशांतरं स्वयं ॥ ये च दुष्टग्रहा रक्षाः पिशाचादे
वयोनयः ॥४०॥ चतुःषष्टिगताः सप्तसप्त एकादश ग्रहाः ॥ अष्टाशीति महाभीताः सप्त
कोटिमहाग्रहाः ॥४१॥ नवतिज्वरभेदाश्च शतभेदाश्च रूक्षिकाः ॥ पंचाशत्खगणोघाश्च निगु

शर
४१

तं कृमिमाग्रहः ॥४२॥ येना रूपस्य यस्त्रिंशान्यिण्ड दानपरायणाः ॥ श्रुतं स्तु दुमे दाश्च
चत्वारिंशत्तिवाव्ययाः ॥४३॥ द्वात्रिंशद्दक्षिवक्राश्च विज्ञा मोऽर्ज्ञारवक्रकाः ॥ चतुःष
ष्ठ्यारतु रूपाश्च ये चान्ये सुदुर्योनराः ॥४४॥ ते सर्वे शाल्मवेशस्य शंखनिःस्वनमोहिताः
॥ विषणास्खलिताः श्रांताः प्राणत्राणपरायणाः ॥४५॥ गच्छन्तु सर्वयो कारो देशान्तरमणि
च्छया ॥ ये चान्ये वनजा ग्राम्या श्रुनेकोरगहश्चिकाः ॥४६॥ आशीविषाश्शिवा व्याला व्याघ्र
ऋक्षेभशूकराः ॥ गृध्राश्येनाखगा काकाः दंशाश्च मशकाम्लगाः ॥४७॥ एते शरभहस्त्याद्य
नखक्षतविमोहिकाः ॥ शुवङ्गकश्छुदाः सिक्ता सिक्तातलनिताडिताः ॥४८॥ स मे दनेन खाः
शीघ्रं नश्यंत्वखिलद्रुईराः ॥ नदंशं तु रगाः क्वापि नाति यामो पवीजितां ॥४९॥ मदहत्वस्य

भक

शर
४१

वह्निरपां त्वाथो न चाधिकं ॥ न वर्षं त्वति दृष्टिश्च न पतत्वशनिः क्वचित् ॥५०॥ नाकाल
त्वतिमृत्युश्च न रोगा नाशुभं क्वचित् ॥ न भीपं त्वं भसि जनानत्वशुभं क्वचित् ॥५१॥ न व
दत्वसहं वाक्यं जंतवो मम देशके ॥ नस्याद्वैरं च जंतूनां अन्योन्यं मम राजके ॥५२॥ भव
तु सुखिनः सर्वे सर्वाः संतु परिव्रता ॥ सर्वाः स्युः संतु सत्पुत्रा नरपुत्री शुभलक्षणाः ॥५३॥
संतु सर्वे श्च नरदंतु कल्याणकारकाः ॥ राजन्वतीमही चास्तु राजा भवतु धार्मिकः ॥५
४॥ संभवंतु पयोगावः फलं त्वौषधयोधिकं ॥ भवंतु फलदाः वृक्षाः सन्यग्भवतु मेखि
लं ॥५५॥ ममास्तु सरसा नूनं मात्मज्ञानमचंचलं ॥ कामक्रोधमदा लोभा संमोहमदम
त्सराः ॥५६॥ मास्तु मे क्वापि सर्वेशा भगवच्चरणानिधे ॥ शरभेश्वर विश्वेश पक्षिराज

शा र ४२

दयानिधे॥५७॥ देहि मे त्वच्चलां भक्तिं प्रणतोस्मि पुनः पुनः॥ गौरीवल्लभ कामारे काल भक
कूटविषादनः॥५८॥ मामुद्धर पदांभोधे लिङ्गेश्वर घ्नांतकांतकः॥ सांबुवेश जगन्नाथ स
र्वभूतहिते रतः॥५९॥ पाहि मां नरसा घोरा दुष्टान्नाशय नाशय॥ कालभैरव विश्वेश वि
श्वरक्षापरायण॥६०॥ रक्ष मूषकचौरेभ्यो धान्यराशिमिमां प्रभो॥ पक्षिराज महादेव प्र
णतार्तिविनाशन॥६१॥ तस्करेण हृतं वस्तु शीघ्रं दापय दापय॥ ये कर्मवादिनः क्षुद्राः रामः ४२
क्षुद्रोपद्रवकारकाः॥६२॥ सदाचारपरित्यक्ता मानहीनाश्च रोधकाः॥ ये जना द्रोहिणस्त्या
शास्ते त्वाल्लोचितभाषिणः॥६३॥ सत्कर्मविघ्नकर्तारः शास्त्रज्ञानपरायणाः॥ ते सर्वे शा
लुवेशस्य तु शूलाग्रप्रपूरिताः॥६४॥ नश्यन्तु निखिलाः दुष्टाः पावकाहततूलवत्॥ ते सा

लुवेशहस्ताग्रखड्गनिर्भिन्नदेहकाः॥६५॥ पतंतु भूतले यान्तु प्राणास्तेषां प्रयांतु त्वरं॥
त्वदंघ्रिध्याननिर्दग्धपापराशेः शायमङ्घ्रिणो॥६६॥ मम दुष्टातिते येषां विभया निक्षयं
त्वरं॥ सदाचारपरं नित्यं साधकं मां विवेकिनं॥६७॥ ये चाक्रमंति संग्रामे ते गच्छंतु पराह
ताः॥ त्वदीयेनैव मार्गेण संचरंतं जयातुरं॥६८॥ जे वदंति परिवारं च प्रांताः शीघ्रं भवं
तु ते॥ त्वद्दासममलं धीरं येमां तर्जयितुं बलात्॥६९॥ मनसा पापमन्यंते तत्त्वां संप्रमतु
क्षणात्॥ मनसा कर्मणा वाचा यद्दुःखं यति दुःसहं॥७०॥ ते महाघोररोगाब्धौ पतंत्वाशु
शिवाज्ञया॥ मदीयानि पदार्थानि गृहीतुं यो बलोकते॥७१॥ ततः क्षणाद्देव नष्टा सो भव
त्वाशु शिवाज्ञया॥ मदीयं द्रव्यमादाय येगच्छंती हतस्कराः॥७२॥ सिंहारिपाशसंबद्धा.

शार ४३

स्तेगच्छन्तु प्रदक्षिणं ॥ श्रीमातीनाश्चये चौरा गृहीतुद्रव्यसंचया ॥७३॥ अश्वेत्राचयवा भक
स्तेतु आगच्छन्तु शिवाज्ञया ॥ तस्कराणि मृगाः स्वानां धान्यवस्त्रधनादिकाः ॥७४॥ पक्षिराज
पराक्रान्ताः समागच्छन्तु ते द्रुतं ॥ समाकृतपदार्थ्याद्देशातीनाश्च तस्कराः ॥७५॥ द्वारमेश्व
हस्ताक्रान्ता स्तेऽआगच्छन्तु सानुगाः ॥ चौरा गृहीतमुद्राः समागच्छन्तु मद्गृहे ॥७६॥ नेत्रा
लुवेशापक्षोतथवातैर्गच्छन्तु सत्वरं ॥ शान्तं विवेकिनं भक्तं त्वदंघ्रीनतत्परं ॥७७॥ ध्रुवं तु रामः ४३
येसहस्राणां स्तेषां यान्तु यमांपुरिं ॥ षट्त्रिंशन्कोष्ठकेयन्त्रे रेखाभूलात्रमध्येगे ॥७८॥ स्वेः
छामन्त्रं लिखित्वातु जपेदाराध्यसाधकः ॥ उदङ्मुखस्सहस्रन्तु त्वरसायेजपेन्निशि ॥७९॥
नष्टाहरणके पंचरात्रं पश्चिमदिङ्मुखः ॥ मारणे सप्तरात्रेन्तु दक्षिणाभिमुखो जपेत् ॥८०॥

योगिणिग्रहनेचाष्टरात्रमाग्नेयदिङ्मुखः ॥ इति गुह्यं महामन्त्रं परमं सर्वसिद्धिदं ॥८१॥
द्वारमेशाख्यकवचं चतुर्वर्गफलप्रदं ॥ प्रत्यहं प्रतिपक्षं वा प्रतिमासमथापि वा ॥८२॥
योजपेत्प्रतिवर्षं वा वरण्यशाशिवो भवेत् ॥ एवं तं जपतः पुंसः पातकं चोपपातकं ॥८३॥
सर्वं विलयमाप्नोति रविणा तिमिरं यथा ॥ दशाब्दं योजपेन्नित्यं प्रातरुत्थाय साधकः ॥८४
॥ सर्वसिद्धिं समाश्रित्य देहान्ते स शिवो भवेत् ॥ त्रिकालं ध्यानपूर्वन्तु जपेद्वा दशपूर्वकं ॥ ८
५॥ कायेनानेन वै देवजीवन्मुक्तो भवेन्नरः ॥ शतवारं जपेन्नित्यं मण्डलं यो वरानने ॥८६॥ सो
णिमादिगुणान्प्राप्य विचरेत्स्वेच्छया सदा ॥ अनलादिधरण्यादि भुवनानि चतुर्दश ॥८७॥ वि
चरेत्कामवद्भूमौ पूज्यमानो यथा सुखं ॥ त्रिमासं योजपेन्नित्यं मष्टोत्तरसहस्रकं ॥८८॥ सदेहं

श्री र शरभेशस्तु साहप्यं लभते वि के॥ षण्मासं योजयेन्नित्यं प्रयतस्तु दृढव्रतः॥८९॥ मद्रूप न क
४४ धारके नित्यैः सर्वसिद्धिप्रदायकः॥ मम लोके तु संपूज्यो विष्णुलोके तथैव च॥९०॥ ब्रह्म
लोके तु रमते सर्वत्राणि वार्यते॥ इन्द्राग्नियमरक्षेशा वरुणैः सप्रभंजनैः॥९१॥ सोमेशा
नकुलक्ष्मीशैर्दिशापालैश्च पूज्यते॥ आदित्यसोमपृथ्वीज बुधश्रीगुरुनार्गवौ॥९२॥ पू
ज्यते स ग्रहैः सर्वैः शनिराहुश्च केतुभिः॥ कल्पैर्गिरपुलस्त्यैश्च पुलहात्रिमरीचिभिः॥९३॥ दक्ष रा मः
कश्यपभृग्वाद्यैर्योगिभिः सह पूज्यते॥ मेरवैर्वसुभीरुद्रैरादित्यैर्वाल्यखिल्यकैः॥९४॥ दि ४४
ग्गजैनितैर्महानागैर्दिव्यास्त्रैर्दिव्यवाहनैः॥ महेश्वरैर्महारत्नैः कामधेनुसुरद्रुमैः॥९
५॥ सरिद्भिः सागरैः शैलैर्देवताभिस्तपोधनैः॥ दानवै राक्षसैः क्रूरैः सिद्धगन्धर्वकिन्न

रैः॥९६॥ यक्षविद्याधरैर्गणैरप्सरोभिः स पूज्यते॥ अपस्मारग्रहैर्भीमैरुन्मत्तैः ब्रह्मराक्ष
सैः॥९७॥ वैतालैः खेचरैर्मन्त्रैः कूष्माण्डराक्षसग्रहैः॥ ज्वालवक्त्रैस्तमोहारैः स्त्रीग्रहैः पाप
विग्रहैः॥९८॥ भूतप्रेतपिशाचाद्यैः क्रमैः सर्वैः स पूज्यते॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरन्यैश्च
जातिभिः॥९९॥ पशुपक्षिमृगव्यालैः पूज्यते सर्वजन्तुभिः॥ किमन्त्र बहुना देवि न च वक्ष्ये
यथातथा॥१००॥ मया च विष्णुना चैव विश्वकर्त्ता च पाल्यते॥ यद् इदं पठते तस्य साध्यं नै
वहि विंदते॥१०१॥ कवचेऽहं महामन्त्रं जपेत्तस्मादनुत्तमं॥ उच्चाटने मरुद्दक्षो विद्वेषे
राक्षसाणनः॥१०२॥ प्राणानता भिन्नहोतु सर्वे त्वीशानदिङ्मुखः॥ ओजपेत्कवचं नित्यं
त्रिकालं ध्यानपूर्वकं॥१०३॥ सर्वसिद्धिमवाप्नोति सहस्रासाधको नमेः॥ देवदेव महादे

११२ वशिवकारुण्यकारिणे॥१०४॥पाहिमां प्रणतं त्वामिन्द्रश्रीदपरमेश्वरः॥ यत्कृतं भ.कं
४५ नत्वकृतं यदकृत्यं कृत्यवत्तदाचरितं॥१०५॥उभयोः प्रायश्चित्तं शिवतवनामाक्षर
द्वयोचरितं॥१०५×॥ ॥इतिश्रीमहाकालभैरवकल्पेप्रत्यक्षसिद्धिप्रदे उमामहेश्वर
संवादे श्रीशंकरविरचिते श्रीशान्त्योपक्षिराज्ञाख्यकवचंनाम एकोनचत्वारिंशपटल नमः
समाप्तः॥ ॥देवशवल्लभराजसुभम॥ ॥ ४५